DPN 6484

सूर्यस्तवराज SŪRYA STAVARĀJ

Title :

Run. No. 7209 Cat. No. 181 Micro. No.

Subject स्तोत्र Hymn Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt.- New. / Maith.- New. / New.- Nep. /

Size in cms. 17·6 × 8·5 Folios extant 1 and 3 only. missing 2 Lines (in a page) 6

Compl. / Incompl. Chapt. / act /

Author / translator Scribe / donor

Date: NS / SS / VS / KS Ruler / place

Script : New. / Dev. / Bhuj. / Ran. / Illus. :

Material : palmleaf / paper / thyasaphu / one side yellow

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

श्री सूर्य्याय नमः ॥ ॥ ब्रह्मोवाच ॥ इत्येदं कवचं वत्सौ कृत्वावस्तवनं रवेः ॥ मुच्य
व्याधि विनि मुक्तौ निश्चितं च भविष्यप ॥ १ ॥

समाप्ति / Colophon

इति ब्रह्मवैवर्त्ते श्रीसूर्य्य स्तवराज : संपूर्णम् ॥ शुभम् ॥

5

0 cmts 5 10 15

श्रीसूर्य्यायनमः॥ ॥ब्रह्मोवाच॥ श्रुत्वेदंवचनंवत्सौ·कृत्वा
चस्तवनंरवेः॥युवांव्याधिविनिर्मुक्तौ·निश्चितंचभविष्य
थ॥ १ ॥स्तवनंसामवेदोक्तं·सूर्यस्यव्याधिमोचनं·सर्व
पापहरंसारं·श्रीरारोग्यकरंपरं॥ २॥ब्रह्मोवाच॥त्वंब्रह्मप राम
रमंधाम·ज्योतिरूपंसनातनं·त्वमहंस्तोतुमिच्छामि·भक्त्या १
नुग्रहकारकं॥ ३ ॥त्रिलोकलोचनंलोकं नाथंपापप्र

हाकुष्टीत्वगलितोत्वक्षुर्हीनोमहाव्रणी॥ ११॥यक्ष्मग्र
स्तोमहाशूलीनानाव्याधियुतोपिवा·मासंकृत्वाहवि
ष्यान्नंकृत्वासमुच्यतेध्रुवं॥ १२॥स्नानंचसर्वतीर्थानां
लभन्तेनात्रसंशयः॥पुष्करंगच्छथःशीघ्रंभास्करंभज
थःसुतौ॥ १३ ॥इत्येवमुक्त्वासविधिर्जगामयत्रयंपुरा
तौनिषेव्यदिनेशानंनीरुजौतौबभूवतुः॥ १४ ॥इत्ये

वं कथितं वत्स· किं भूयः श्रोतुमिच्छसि सर्वविघ्नहरं सारं
विघ्नेशविघ्नकारणं॥ १५ ॥ स्तोत्रेणानेन तं स्तुत्वा मुच्य
ते नात्र संशयः॥ इति ब्रह्मवैवर्ते श्रीसूर्यस्तवराजः सं
पूर्णम्॥ शुभम् ॥ ॥ राम ३.

१८१ सूर्यस्तवराज